

कविकुलगुरु - कालिदास - संस्कृत - विश्वविद्यालयः



Acc. No. ~~4730~~ M-1595

Title - भावविलास.

Author - रुद्र (विद्यानिवासपुत्र न्यायवाचस्पति)

Date - ?

Subject - काव्य.

folio - 32.

Xerox - 63.

श्रीकृष्णायनमः॥यःफुल्लकुन्तफालकुणेरणकुविप्रोद्भवतापानल
ज्वाला त्रिःप्रतियद्भःपक्षविपिनश्रेणीर्ददाहक्षणात्॥योकृष्णे
स्सरकृष्णरूहोचजगवद्वासो निवासः श्रियांतस्मादादाविरकृष्णे
तम हिमाश्रीमान सिंहोन्टपः॥१॥संयामोद्दामधामप्रतिक्रटपत
नकंठरक्तोपरक्तायेनाकीर्यस्वसेनाश्वकुरुदधिजलैःक्षालित
रक्तधारा॥गाढंदास्त्रात्रिघातादरिमदकरिणांदानमाच्छिद्य

सद्योहस्तोन्यस्तं च येन क्षपित रिपुकुले द्क्षिणोदक्षिणेन ।। रत
त्वखड्गाघातजातव्यथ रिपुवनितामुक्तबाष्पांबुधारासाराद
राक्कुदारादिशि दिशि सरितो नोद्भूता श्चेद्भवेयुः कल्पांतक्रूरस्फूर
प्रकरविजयिनो विस्फुरत्तत्प्रतापात्पारावारोन पिसपदिप अनपारा
राश्शुष्यतः पूरयेत्कः ॥ ३ ॥ श्रीमान् श्रीमान सिंह क्षितिपति
त्पलघैरुद्धतो जाव सिंहः पूर्णः पीयूष ज्ञानु वितरण किरण

ध्वस्तादैन्यां चकार: ॥ स्फारस्फारास्तुषाराचलस्फुरतटिनीहंस
हारानुकारा: कीर्त्तिज्योत्स्ना: पिबंति प्रतिदिनमनिशं यस्य विद्व
॥२॥ च्चकोरा: ॥४॥ यस्य स्फारासिधाराहतिदलितकुलजुष्टख
ड्गप्रमुष्टिप्राच्योदीच्यप्रतीच्यप्रनृतिनृपतिश्रेदंरितापष्ठ ॥२॥
लक्ष्मी: ॥ हर्षादुत्तंसयंते दिवि दिविसुहृशोन्तरिशोयस्य नित्य
व्याकोषं कीर्त्तिपुष्पं चतुरुदधितटीवृक्षवाटीविलासि ॥५॥ रि

गन्तुं गन्तुरंगवं घुर रघु रक्षःक्षमामंडलक्षान्यच्छू लिपल्लैरंपराङ्ग

ल धरध्वस्तावि षिव्यौम निदोष्णो र्यस्य करालैरसनो कल्याक्षपाणीं

लता विद्धकद्व ल्लि रिवा नि संब ति दि शं लो कैरलो किंप्रजो: ।।६।। य

ंकुं प द्विपदानवा रि जिर न्न संग्राम न्न: पं किल: तस्यावै. रि

करीद्र मौ क्तिकामयं बीजं च येना हितं ।। तस्माद विर न्न द्य

दास्ता रुरयं तस्योद्गता: कोरकास्ता रास्तोषु वपूर्णचंद्रकप

क्रा.ल.

॥३॥

दादेवैकानज्ञटं जते ॥७॥ चूर्णं तेतूर्णमेते कुलधरणिभृतो द्वि
ग्द्विपा दिग्विदिक्षु क्षुभ्यंति क्षोभ्यते ॥ यंति क्षितिमतिविकलो
दिता मर्मणा कूर्मराजः ॥ प्रस्थाने यस्य गर्जत्करटिघन
घटासंभ्रमन्यंचदुर्वीमुर्वीद्दर्वीकरेंद्रः कालयितुमुदित
श्वासमार्त्तिविकर्त्ति ॥८॥ यो सौभत्यर्थिनारीनयनजलजल
स्पोन्मिषन्नीररराशिप्रोन्मीलकीर्त्तिचंद्रः क्षितिपकुलम

॥३॥

णिर्न्नु चं ग्रावतंसः॥ यद्दोरुद्दामचापध्वं निर्ज्ज निर्ध्रुषो
ज्ञामदग्न्यस्य रामज्र्या निर्घोष ज्रमेण ज्रमति विवलित
स्याणणा दिक्कूट पृष्टैः॥ ७॥ खेलंतीर्व्योमगर्ने दिशिवि
दिशिमुद्रून्नि व्यंतंतीहरंती ग्राश्चन्प्रोढं धकारान खिल
ज्ञान मुनौ विस्मयं वर्द्धयंती॥ यस्य स्फार सिधारात दि दिव
तरलावैरिकं वोपकं ठं प्राप्तास्सद्योनटी वप्रणपकुलुकिनी मोह

मा विः करोति ॥१०॥ यस्यान्निः कोपपुंञ्जेव सैतिखुरपुटे वाजि
नां गंधवाहो लक्ष्मीः सस्नेहदृष्टो कमठकुलमणे वांछितावा
मधीशा ॥ शैक्षे कौक्षेयकाग्रेक्षपित रिपुगणे कोपनो सो हु
॥४॥ तांतः कसत्संश्रीज्ञाव सिंहं प्रबलमखवन्नुज्ञामाश्रयं नाश्रयेत ॥४॥
॥११॥ रत्नान्यंबुधितो यगर्जमृगमन्मेरुः सुरान् त्रिश्रियेस्वी
यांके कमलां निधाय निदधौ निद्रां हरिर्नीरधौ ॥ यस्मिन्
दिसति क्रूरिदातरि त्वगुणां ज्ञालस्थले दुर्लिपीव्रीडानम्र शिराः

कमंडलुमयं न्ययाह माष्टुं विधिः ॥१२॥ पादैकं कणामर्प्पयंतिक
रयोर्मंजीरमातन्वते कांचीदामचकुर्वते कुच तटे हाराति नं वे
षुच ॥ नेपथ्यग्रहणे वनायगजनुषा मेणीदृशो न्हरिशोय स्मि
न्नदानगुरोमहीसुरतरौ विश्वधांजनरां विजृं ति ॥१३॥ धूत्का
रेण कुमूषिकस्यकटुभिः कीटांतराणां रवैर्बालानां रु दि

॥५॥

तारवैरपिचयेनिन्युर्विनिद्रा निशाः ॥ यस्मिन्॥दातरिया
पयंतितनइमेड्रूषास्वनैर्हहितैर्वामानांकरकंकणध्वनिर्नि
रप्युज्झागरायामिनी ॥१४॥ यस्मिन्दिवसतिदातरि द्विज
नुषोदर्जांकुराकर्षणक्रूरैः पाणितलैर्वघ्रस्तनतटेव ध्रं
तिमुक्तास्त्रजः ॥ शीतोष्णश्रमकर्कशैरतिकठोरांगैः प्रियालिं

॥५॥

गितैः कांतारुक्मपरिच्छदाः त्रात्रि निजाः त्राप्याः स्वमध्यास
ते ॥१५॥ ऐश्वर्यं नहुषस्य विष्णु विषयश्चर्यां वरीषस्य सापां
डित्यं धनुषश्च पांडुतनुषो गांभीर्यमंभो निधेः ॥ दातृत्वं
बलिकर्णयोरिह जगत्यैकत्र चेत्स्यात्तदा तस्यश्रीयुतना
व सिंहनृपतेः साम्यं समुन्मीलतु ॥१६॥ काव्यालापक
लाकलापकलनावैदग्ध्यदीक्षागुरोर्भूमीकल्पतरोरशे

षज्जनतासंगीतकीर्तेरिह ॥ तस्याज्ञामधिगत्य यः कविकु
लानंदाय संपादितः संदर्भस्तामममत्सराः कृतधियः कुर्वंतु
कर्णातिथिं ॥१७॥ जिह्मो लोकः कथयति पुरो हंत हित्वानु
॥६॥ णौघानं नः साहं गुणगणनिधेस्तस्य रत्नाकरस्य ॥ विश्व ॥६॥
विद्यानुसरणसमारूढ सर्वेंद्रियाणां दोषे दृष्टिः पिशुनमन
नस्यांनानुरागो गुणेषु ॥१८॥ गुणिनां गुणेषु सस्वपि पि

श्रुनज्जनो दोषमात्रमादत्त ॥ कुसुमे फले विरागी ऋमेलकः

कंटकौघमिव ॥१९॥ सुज्जनानामपि हृदयं पिशुनपरि

षंगमलिनमिह भवति ॥ पवनः परागवाही रथ्यासंगेरज

स्वलो वहति ॥२०॥ लोक एष गतलोचनत्रपः कस्य वाना वि

दूषणो नु वाच्यतां ॥ लोचनोत्सवमनेषज्जीवनं यत्कलंकय

रो

॥७॥

तिचंद्रमंडलं ॥२१॥ पिशुनसमारोहसि किं सुजनसमाज्ञा
न नीष्ट सौजन्यः ॥ करटोपि किन्नु लभते ॥ कलकंठपदं र
सालमौलिगतः ॥२२॥ द्विरदरदनप्रौढाघातान्न ताहशास
भ्रमः परस्तुपतनादस्य त्रासो न हं त तया विघः ॥२३॥
आपातमलिनिमासौ सहृदयहृदयेन दोषाय ॥ अंगा
रयोगजन्मा निसर्गशुद्धे यथा स्फटिके ॥२४॥ केनादि

॥७॥

ष्टौ कमलकुमुदोन्मीलने पुष्पवंतौ विश्वंतोयैः स्नपयितु

मसौ केन वावारिवाहः ॥ विश्वानंदोपचयचतुरो दुर्ज्ज

नानां दुरापः श्लाघ्यो लोके जयति महत्तामुज्वलोयं नि

सर्गः ॥२५॥ कस्मादिंदुरसौ धिनोति जगतीं पीयूषगर्भैः

करैः कस्माद्वा जलधारयैष धरणीं धाराधरः सिंचति॥

x5

॥८॥

ग्रामंग्राममयंचनंदयतिवाकस्मात्रिलोकीरविः साधूनांहिप
रोपकारकरणेनोपाद्यपेक्षंमनः ॥२६॥ तोयानामधिपति
राकरोमणीनांशैलानामअयपदंमहामहद्भ्यः ॥ अयाद्यो
अवस्मियदित्वमेवतावत्कोनुस्याज्जगतितदाज्जनो
वलंवः ॥२७॥ कुंभोद्भवस्यकरपुष्करकोषकोणपाथोनि

॥८॥

धौ विधिवशाद्द्विपदं प्रयाते ॥ यदुल्लसत्त्रिदिवलोकवि
लासिनीनां ते पंकसीमनि महामणयो लुठंति ॥२८॥ ग
रलं यदि ज्वलदराशेरिदमुत्पन्नं किमेन ॥ तेनैवास्य तु महि
मा यदन्यत्पीयूषपारिजातादि ॥२९॥ पीयूषपारिजाता
द्याः केन न्यूवन्पयोनिधेः रत्नैरेव तयाप्येष रत्नाकरपदं
गतः ॥३०॥ गुणिनः क इव विशेषो गुणरहितेज्ञनने निरण

॥ ९ ॥

प्रियेन विहाय गुणाश्रयमगुणेगाढानुरागासि ॥ ३१ ॥
हरिस्त्वा विनिसिंधुसंजवेकमले किंकथया मितेगुणान २॥
त्वनुरज्य सिहाप्सडेज्ञनेगुणगौरे पुरुषे विरज्यसि ॥ ३२ ॥
मधूके माध्वीकं पिवसित्रातपत्रे त्निरमसे मधूलीपाली
त्निमधुपसहकारे विहरसे ॥ वसंते वासंतीमधुमधुर
मस्मा सिवकूरोदुरावेरोगयंतेतदपिकुटज्ञेय द्विचरसि ॥

॥ ९ ॥

॥२३॥ मधूलीमत्त्विष्यनमलयपवनोन्मूलितदलेमुधामु
गधः कुंदस्तावकनिकुरुंवे विचरसि॥ इतःकांतादंतछेदन
वसुधासारमधुरेवधानप्रेमाणंमधुकरनवांजोजम
धुनि॥२४॥ निःशंकंगजपतिगंडदानधारामाराध्यक
मरदिनान्यनून्यनैपीः॥ यावंतस्फुरतिकरालकर्णताल
स्तावत्त्वंनवनलिनीवनीमुपेयाः॥२५॥ मधुनवसुधास्वा

दंतादृढ्विपाप्य निरंतरं निशि निशि निज्ञक्रोडे कामं यया सि
निवेशितः ॥ स्मरसि किमु तामेतामद्य त्वदेकपरायणां भ्र
।१०॥ मर नलिनीं दिक्षु भ्राम्यन्लतान्तलंपटः ॥२६॥ इह रू ॥१०।
पमात्रसारे चित्रकृते कमलकह्लारे ॥ न रसो नापि च ग
घो मधुकर वंधो मुधा परिभ्रमसि ॥२७॥ न चेतस्त्वां पे
यस्तावकमकरंदे निरमते समुत्कंठाका चिन्नवबिकच

पुन्नागमुकुले ॥ न मल्लीवल्लीनामपि मधुनि वांछा मधुलिहः
समाघ्राय त्यक्तो यदवधि लवंगीपरिमलः ॥२८॥ भ्रम स्वैरं भ्रां
तर्भ्रमरनवयूथीषु वकुलेषु मधूलीमल्लिष्यन् कुमुदनवीथी
षु विचर ॥ वसंतप्रारंभस्फुरितमधुसंभारसुभगो न ते
विस्मर्तव्यः क्वचन सहकारव्यतिकरः ॥२९॥ आस्वाद्यात्र

मधून्निषद्रूपदमदं मागाः कषायांकुरैर्माकंदेन पिकान्यता रितव
नाम्रूर्द्धानमध्या सितः॥ प्रत्यासन्नतमे पिके पिजवतेयेनार्पि
तानाहृत्वामा ध्वीतस्य विवेके विच्युतिरियंस्साद्गुण्यमतन्नते॥४०॥
१॥ नीरजान्यपि निषेव्य निर्झरं नीरजानि कुटजानि वांछसि॥ ११॥
चंचलत्वमिह चंचरीक ते साहजं कथमिदं विमोक्ष्यसि॥४१॥
पीतमत्रमधुयापिताक्षपाभृंगसर्वमचिरेण विस्मृतं॥ हायमा

नस्तुषमां हिमागमे पद्मिनीय द्दिहनावलोकसे ।। ४२ ।। एणी।द्दशः
श्रवणसीम्नि पदानयं तितेनैव तस्य महिमा नवचंपकस्य ।। चं
तत्र नो विहरसेय दिन्नंगतेन नैनैतस्य किंचिदपि तत्कृतवैव
हानिः ।। ४३ ।। गलितानि मध्धूनि सर्वतो विनिकीर्णनिदलानि
मारुतैः ।। अद्युनापि न हंत माधवीमधुपैना मिह नाममुंचसि
।। ४४ ।। उपानीतं दूरत्सरिमल्लमुपाघ्रायमरुतासमायासीदस्मि

॥१२॥

न्मधुरमधुलोन्मान्मधुकरः॥परोदूरेलान्तः कुपिपा ाणिनश्चंदनत

रोः॥पुनर्जीवन्त्यायाद्युदितदिहनान्नोयमनुलः॥४५॥ग्रात

ग्राम्यलवंगवल्लिषुपिवस्वैरंनवांन्नारुहेमाघीमाधविकामधू

निमधुराण्याकंठमास्वादय॥कस्मादापतितोसिकेतकमि

दंयस्मिन्नुदीर्णरत्नोदृष्टिंलुंपतिस्तचयःप्रवितताःकृतंतिम

र्माण्यपि॥४६॥सहस्रासमयेसमीयुषोरुचितासंगवि

॥१२॥

त्रोषस्न्ययोः॥ इहषट्पदपंकजन्मनोर्नमनोज्ञा निरसावपेष्यति
॥४७॥ नालिंगितानवलवंगलतानचापिसंज्ञा विना विटपिनः
कालगुंजितेन॥ श्री सादितासपदि काचनरातिरन्यामाकंदको
रकामुदीक्ष्य मधुव्रतेन॥४८॥ किन्नपत्रयसि • महेंद्रदिङ्मु
खेरखेचरीनदीधितिरसावुदंचति॥ मीलितैवनलिनीहमा
कथास्तन्मधुव्रतमुधागनागतं॥४९॥ • कुंदकुड्मलमुपा

॥१३॥

स्यतांलयापद्मरीत्समयोतिवाहितः ॥ चंचरीकपरिहीन
सौरभ्यारोचतेनन्नववतेसरोजिनी ॥ ५० ॥ अपेममधुपमा
रूथावतह्यामनोदीनतांतुषारसमयेल्लतान्तातनिषेव
णव्याकुलः ॥ इयंपुरतएवतेसरसपुष्पमासोदयेरसा
लनवमंजरीमधुकरीजरीज्यते ॥ ५१ ॥ चंचरीकचतु

॥१३॥

रो सिचं द्विकावैजवेकुमुदिनीनीषेवसे ॥ भास्करे ज्ञ यि नि

पुष्करे करैरुन्मिपन्नवदले कुरङ्यसि ॥५२॥ इतोवसंतहे

मंतद्वैराज्या दिवदुर्मनाः ॥ न कुंदेना पिमावंदेपदंवध्नाति

षट्पदः ॥५३॥ मागाः खेदं कमलकिरणैरेष पीयूषगर्भैः

प्रालेयांशुर्यदिह कुसुदामोदमाविःकरोति ॥ नानुग्राह्य

पद सिमहत्ता मौद्दन्नानामयंतेमन्ये कालादिहपरिण

27

॥१४॥

तः प्राक्तनो दुर्विपाकः ॥ ५४ ॥ यावत्त्वां न खलु हसंति कैरवि एषो
यावत्त्वां तरणिकराः परामृशंति ॥ यावत्तेमधु विन्नवोन
वोस्ति तावन्मा धीकं चितरसरोजषट्पदेभ्यः ॥ ५५ ॥ रुचिर
तिरश्चिरांशुबिंबमुच्चैः स्थिरसितः स्वयमेष शंकरेण ॥
कमलिनि मलिनीकरोषि कस्मान्मुखमिदमिंदुमुदी
क्ष्य लोककांतं ॥ ५६ ॥ नलिनि निपुणतां वदामि किं ते ग्रम

॥१४॥

॥१५॥

र विलास चिब्बोष लालसायाः॥ त्रिभुवननयनोत्सवंय दिदृक्षुन
य सिन हृतदृगंतवर्त्मसीमां॥५७॥ नकुलेनचा पित्रालेनच
पिरूपे स्तिक श्चिदुत्कर्षः॥ यत्पुष्पा सि मि लिंदानर वि
द महत्वमेतत्ते॥५८॥ वैमुख्यंमृगलांछनस्य मनसो नि
र्मातिमेन व्यथां नोदूये चिरला लितामधु लिहः सपंतिय
न्नां तिकं॥ ज्योन्यांतीवदुरक्षरा णिमधुपश्रेणिध्वनिछद्म

॥१५॥

29

नायत्कादंवकुमुद्वतीहस ति मांतन्मेमनस्ताम्य ति॥५९॥
मरंदलोत्नान्न मि लिंद माला जेद्लेन चालाश्रवले निनाय
हाहंतनालीक मिदंदु रंतत्रा ल्लेयपालीकवलीचकार॥
६०॥एकस्मिन्रह्म निरावयोः समङ्म निस्वच्छेस रोवारि
णि भ्रातः किंचसहैवकानि चिदहान्यत्र्व्यतीतानिनौ॥ल
ब्धंतामरसत्वयाम्त्गदृशांलीला॰वतंसास्पदंशैवालं विलु

ठा मिपामरव च्चूपादाहतेपाथ सि॥ ६१॥ विच्चम्यकानन
मस्रौ दिवसावसाने त्वय्येव षट्पदयुवाह्रदयं ववंध॥
५६॥ राज्ञीवचेन्मल्लिनिमानमुरीकरोषि कः स्यादहो मधुलि १६॥
हाम धुनावलंबः॥ ६२॥ मिलतिमनोज्ञे मनसा मालति
मलिने नवारिवाहेन॥ कुसुमाकरे विरज्य सिमुग्धे वैद

ग्धामी दृष्टां कस्याः ॥ ६२ ॥ सौरन्ध्येण समाहूषि णिक कुन्तः पु
ष्पासि पुष्पं धयान् लूतातंतुहतस्तथापि किंयतीस्त्वं यापयेर्या
मिनीः ॥ अस्मिन् रुद्रासपुरे पुरस्तात इतो विन्यस्त विश्रामिषे मा
लाकारम्रतेलवंगल्ल लितान् कस्ते गुणान् ज्ञास्यति ॥ ६७ ॥ सं
दर्प्यपि स्वम घुवै नवमस्ति यत्ते रकेंद किंदुरत्नि मान मिद्दात
नोषि ॥ एतन्नचेतसि करोषि सरोजबंधुः पुष्पंधयो पिम

॥१३॥

चिसौहृदमातनोति॥ ६५॥ एष षट्पदयुवा यदायतः कुंदयापयति यामिनीस्त्वयि॥ दुर्वहातदपिनापचीयते पद्मिनी विरहवेदना हृदि॥ आस्वाद्यौषकषायमंकुरमुरुप्रेमानुबद्धाशयो माकंदस्य यत्रां सिको किलयुवा निर्माति दिग्भित्तिषु॥ माध्वीकानि निपीय तस्य मधुपास्त्रैवरुज्जंत्यमी कोवृत्तामसतांचचचरस्त्रां वर्त्माति गैचोष्टितं॥ ६७॥ न परूपति लवंगिकां

॥१७॥

नच निषेवते मालतीरसालरसिकः पिकोननलिनीमंचति ॥
अवतमपुमीहृतेमधुपलक्षपक्षानिलाः क्षिपतिपदमुज्जनेऽ
यतिनचैवेवायत्राः ॥६८॥ शाश्वन्निसर्गमलिनाः सहकारका
मंलुंठं नितान्यपिमधू नितवद्विरेफाः युक्तंनतत्तवकषायर
सैःप्ररोहैरेतान्प्रतारयसियत्कलकंठहूनः ॥६९॥ स्निग्धा
ग्नाःफलिनोदलत्सरिमल्लैःपुष्पैर्मधुस्पंदिनोनानंदायज

॥१८॥

वंति किंचनन्नुवांन्न मीरुहोन्न रिन्नाः ॥ माधुर्यमधुनस्त्वैव
परमं माकंदे मन्यामहे माध्वीममर्मविदोद्दढमधुलिहः स्यूतय
तामममर्णि ॥७०॥ विमुक्तावासंतीवकुलकुसुमेष्वरणमपिन
कोपिक्षितिरुहः ॥ यमाकर्ण्योत्कंठातरलमिहन्नंगेनच
लितं विदूरान्माकंदः सखलुदलितोद्यूथपतिना ॥७१॥
उन्मीलयंतिकुसुमानि मनोरमाणि केनाम नात्र तरवः

॥१८॥

समयो चिना नि॥ कस्येदत्त्वां कथय यदोहदमस्ति तस्य पादद्वि नि
र्मित मशोक महीरुहस्य॥७२॥ गर्वायसे विक चकोर कपुंजगुं
जद्दृत्तषट्पदघटा विजवेन किन्नु॥ वामकवांचरण ताडनदो
हदा नि किं नाम न स्मरसि तावद त्रैा कता नि॥७३॥ करटके
लकंठशावकमेतं पृच्छसि किं मुधायासे॥ अयमिह पुरा
सपक्षः परिचयमपि तेन जानीते॥७४॥ कलयसि स्मरणाल

॥१९॥

कंद विसिनीदलेषु सानंदं ॥ अयि राजहंस त्वं सत्यजसि मनोहारिक
थमिदं चारि ॥१५॥ नेदं सरः स्मरसवारि नवारिजं वा नैतन्म धूली
मधुपाः सहवासिनो वा ॥ हे मार विंद वनवास विलास वासौ ना
ज्ञो रे हंस मानस जुषस्तव मानसोऽपि ॥१६॥ अत्र स्नात मिहो
पभुक्त ममलं त्वयो मृणाली दयैलं याच्यां त्राख्य दिक्षान्य त्रुयत
सुखं कल्लोल हिंदोलजं ॥ कष्टं तावदवरा निध्व निप्रणयिभिः प्रो

॥१७

37

दानिलास्फालितैः स्फारां ज्वो धरमंडलै र्विघटितौ चंक्रांगच

क्राह्वकयौ ॥ ७७॥ दूरादेष निशां निरस्य कक्कुज्जामुन्मूल्य गाढं

तमःप्रेमाणं पुवयो र्व्यंन क्तितरणि र्विश्लेषदुःखं नुदन ॥ एतस्यां

गरथांगचंडमहसो मार्गाः समीपं व्रजन्नर्ख्यातिं द्वास्य सिनिष्य

तिष्यसिपुन र्निर्दग्धपक्षः क्षितौ ॥ ७८॥ ज्ञायानैव विज्ञावरावि

भज्जतेनौ निर्दयोयं विधिः स्वस्तापां गिरथांगिपक्ष्य सिमुधा

चित्तव्ययां मा स्म कृथाः॥ दैवं संप्रति गर्हयाववक्ररो। निर्मायये
नावयोर्मर्मप्रेम विनिर्मितः प्रति नि॥ रां विच्छेदखेदो महान्२॥
॥२०॥ ॥७९॥ कूपेन्त्वां सिपिवं कूपर सिका वापीषु वापीन्दुषोना॥ ॥२०
दियास्वपनत्रिणो पिस्य रितोमा स्वादयंतामयः॥ सारंगस्य
नन्तो निवेशितहद्वाः किं तेन यावन्महीमन्तो न्तिः स्नपयन्नसा
कुदयतेन प्रावृषेण्यो घनः॥८०॥ तापं त्वं प सिसर्वतो वितनु

षेमुक्ताफलंस्मुत्तिषुक्षेत्रं सिंच सि चिंचपल्लवय सिश्रीरवंडमु
रव्यान्दुमान्२।।क्षारक्षार मिदं जलंजल नि धेरादाय जीमूतहे
विश्वंी जीवय सिब्रवीतुज्जगतिप्रोदो पिकस्तगुणान्२।।८१।
कुषरेषु विवरेषुवांजसंसीवीचयो पिजवताप्रवर्तिताः।।क्षेत्र
सिन्नि निहितास्तु विंदयोवोवा रिवाहजवतोनवोनयः।।८२
संपादिताः सपदि दर्दुरदीर्घनादायन्को किंलरुता नि नि

लाक॰

॥२१॥

राकृतानि॥ निष्पीतमंबुलवणेनतुदेवनद्याः पर्ज्जन्यतेनभवता
निहितो विवेकः॥८३॥ षत्तद्दतोषु नलिनेषु नपक्षयातोज्ञातो
वतस्फुटमसोकुटजेनुरागः॥ विश्वैकजीवनपटोरपि
वारिवाहदुर्वारवायुवनरागस्यनतद्विचित्रं॥८४॥ नैवामीप्र
भवंतिचातकचषाविछेदसंपत्तयेप्रागल्भ्यंदधतेनहंतहरि
तांमंतापदांतावपि॥ प्रक्षामास्तारणिविषोपिनतिरोधा

॥२१

41

त्तुंसमर्थाः पुनस्तादृशाः पिच्छिलयंति केवलमपां लेशोऽपथस्तो
यदाः ॥८५॥ उद्दामद्रुमकमणिमयूषमच्छिन्तानामेतेषामहह
महीरुहामिह स्यात्॥ आलंबः क इव दिवं भुवं पयोभिः
सिंचंतं जगति विहाय वारिवाहं ॥८६॥ संतापं जगतो वि
लुपसि धरां धाराभिरासिंचसि क्षेत्राण्यंकुरयस्यमूनमु
कुलयस्यह्नाय नीपद्रुमान् ॥ सारंगस्य न जो निवेशितन

दृष्टाश्चं चूपुटीपूरगो वै मुख्यं वहसि च मंबुदय दिग्नत्येनु को
नाम तत्र ॥८७॥ तानि तानि कमलानि तज्जलं तानि षट्पदकु
॥२२॥ लानि ते खगाः सर्वमेकपद एव विच्युतं पंकशेषमचिरादभू ॥२२॥
त्सरः ॥८८॥ नावर्त्तो न च तरलास्तरंगमाला नेदानीं जलरयजा
रवाः करालाः सैवत्वं तटिनि तटद्रुमान् विपाद्य प्रौढानामप
यतासि हा सिपात्रं ॥८९॥ वापीकापि कदापि न श्रुतचरी

कोबेद कीदृकूसरोव्योमांत्नोज्ञवनीवचात्रतटिनीकैर्नी
मनङ्गायते ॥ हंहोपांथदुरंतसाहसत्न रे नैहागतंचैन्मरौ
मंदूकाकुलपंकसंकुलतलादंधोः कबंधंपिव ॥ ९० ॥ म्र
लंकूलमहीरुहां विरुज्ञति क्लिश्नाति तुंगास्तटी विश्लेषं
चरथांगयो र्वितनुते राज्ञी विनीकर्षति रयामाः शैवल
वल्लरीर्विवृनुदति ग्रस्नाति वीवीः क्षणान्किंतद्यन्नकरोमारु

॥२॥

तवत्रा दंज्ञो न्तरः प्राट्टषि ॥ ९१ ॥ राज्ञा विना विपिनसोर
न्नसारगंधियोंमू द्वसंत दिवसेषु ज्ञनैकबंधुः ॥ रथ्यारज्जं
सिवि किरन्न विरुज्ञन्नगेंड्डानुन्मत्तवद्भुम तिपत्रयतस्यो
घवायुः ॥ ९२ ॥ गंधवाहगहना निगाहसे गंधज्ञात
मिहसं चिनो षि च ॥ नैपुणाच्युतिरियं तु नावकीयन्न
तत्त्र सदस द्विवेचनं ॥ ९३ ॥ निधेः कलानामपि शीतिरेषाम

॥२३॥

र्गा ५ णिगमेस्संस्पृशातीवन्यूयः॥ कुतो विशेषात्कुमुदेषुरागः।
कुतो विरागश्च कुशेशयेषु ॥ ९४ ॥ रंजिताननकुतो निर्वेशिताना
र्चिषो वत चकोरचंचुषु ॥ कष्टमिंदुरुदयन्निपीयते दारुणेन नमसा
वलीयसा ॥ ९५ ॥ लक्ष्मीकेलिगृहे कुशेशयदृशां पाणिद्वंद्वो
हि णिस्यामास्तलकस्सुधासहोदरमधुप्रस्यंदसंदोहिनि ॥ जीवा
तुस्त्रिदिवैकसां त्रिजगतामाप्यायने चंद्रमस्त्वं चेदं वुरुहे नर

॥२४॥

न्यसितुणश्लाघातदस्तंगता ॥ ९६ ॥ श्रेयान् विघोर्वद्धकुलपक्षप
रिक्षयो पिनोपूर्णनापिज्जल्लघेरिहवर्णनीया ॥ पद्मा रिनस्त्वश
तिहंतनष्टथग्जनो पियस्या स्तैर्मरवत्कुलो पिमुदं जज्ञते ॥ ९७ ॥
श्रारोपितः शिरसिपः स्वयमीश्वरेण सिक्तः स्वदैवसुरत्नैवति
नीज्जलेन ॥ नक्षामतां नदपिमुंचति सोयमिंदुरेतद्दानत्किदुर
तिक्रममेवदेवदैवं ॥ ९८ ॥ इंदोर्निंदतु नाम धाम नलिनी मिंदं तुवका

॥२४॥

क्रियानैवानेनस्तु धाकरस्यस्तुषमाह्वा निर्नवाद्दुर्यत्राः ॥ एतैनैव वक्रतार्थं
तास्यऽननतायन्मोदमालंबते पङ्क्योक्तास्तु चिरंचकोरप स्त्विद्धं
चूपुटंन्यस्यति ॥ ९९ ॥ यामहेन्द्रा त्रिरसो विन्द्रूषणां या त्रिलो
कऽननलोचनो स्वःसेय मिंदुकलिका दिनागमे तापिताक मिवह
नातितायल ॥ १०० ॥ उत्साहं वनितासरवेषु विरहम्लानेषु दैन्यं त्रास
शोकं कोककुटुंबिनीषु दिशा निक्षेमं वकोरेषु च ॥ लक्ष्मीं लुंपति

२५॥

पंकजस्य कुमुदामोदाय संपद्यतेतद्वीजं ध्रुवमत्र पूर्वं विहितं
द्वेषस्य रागस्य च ॥१॥ धुनोति ध्वांतानि व्यपनयति नीहारप
टलं कुलं राजीवानां दलयति रथांगं रमयति ॥ जगद्व्यापी
देवोजनपतिजनानां चनयपनंनयाति स्थेमानं क्वचनवद दैवं
जयति कः ॥२॥ अरविंदानि विंदंति व्यथां विरहतो रवेः ॥ तेषां
विरहतस्तस्य न ज्ञाने कीदृगंतरं ॥३॥ येनत्रैरावपदे मदे

२५॥

जराकुंडसीम्नि नरवैरैर्विखंडितं ॥ यौवनोत्सवमवाप्य केसरी केषु द
र्शयतु सोद्य पौरुषं ॥४॥ भूमिपाल भुवने स केसरी पंजरे स्फु
रति रुद्धपौरुषः ॥ उन्मिषत्सु करटेषु दर्शयत्कं जिनातु कः करोतु
करजार्पणोत्सवं ॥५॥ एतस्य केसरपतेर्गिरिकाननानि तानि
स्मरंति परमस्य पराक्रमस्य ॥ अद्याति दुर्वहजराविकलस्य
कोनु प्रत्युतानि चरितानि चिरंतनानि ॥६॥ मग्नं मत्तैः सरसि

॥२६॥

करिभिर्विदूनेऽपि मुख्यैर्लीनं कुञ्जे तावरपतिभिर्मूर्छितं रंकुस्थैः॥ आकर्ण्योच्चैरिह मृगपतेर्गर्जमानस्य नादान् कैः कैः किं किं न खलु चकितैः कानने स्मिन्नकारि॥७॥ स्वैरं रसेरिन्नपूयपैरिह सरःस्थं गेन विक्षोभितं तावन्न्यं कुकुलचन्द्रकृतिना ते विद्रावितं द्वीपिभिः॥ हेलाक्षिप्तपदे पराक्रमनिधौ वुल्गन्ते माणेहरौ चित्रं सैव तदैव चित्रलिखितेवासीदरण्यस्थली

॥२६॥

॥८॥ माद्यत्कुंजरकुंभकूटविगलन्मुक्तावदातांतराः किं
चिन्नोपकषायितेनमनसा येनाद्रिपादाः कृताः॥ सोऽयंस
प्रति दूषिका कुलदृशा कष्टां दशामागतः सिंहः पांसुकि
रेणशावकैश्च करखुरोन्मुक्तैः समाकीर्यते॥९॥ गर्जद्गहे
न दलयंति करेणुकानां गंडूषयंति गजगंडतटीमदांभः॥
यद्भर्त्सिता निजरयामुषितः स एष कंठीरवः परिभवं सहते मृ

गेन्त्यः॥१०॥ मीलितेक्षणमिदं विगाह्य सेवारणेंद्र गहनं नवीक्षसे
॥ अंतिके त्वण विमुद्रिताननः कूपएष खलु दुस्तार स्तव॥११॥ त्रो
वला नि त्रिार सिप्र तीक्ष्ण तः पङ्क्तिरेव कमलो निलुंपतः॥ स्वैरिण
स्तव सरो विहारिणो वारणेंद्र विदितो नवो नयः॥१२॥ नैवावां
समहीरुहं विरहयन् लीलासरो नत्यजन् विश्लिष्यन्न करेणु
का ज्ञिर ज्ञितः श्लिष्यन्नवाकंटकान्॥ एवंनाम विद्रूय॥ तेम रुम

हीमासाद्यम ध्यं दिने संतप्ते कल त्रैर्यथा करिपतिः कांतारगा
त्ताम्यति ॥१३॥ नस्वांकरेणुम पिनापि निद्रान्न किशोरान्ना
त्मानमेषप रित्वोच तिचारणेंद्रः ॥ दावाग्निमत्त तनुस्त्र यथो
पसन्नान्न दानार्थिनोम धुकरानुपरुढ नावान् ॥१४॥ दैला
कुड्न लितेक्षणेन करटं कंडूयतोन्मूलिताः शाखाश्चु वितेचं
द्विविवपुषेन्मूमीरुहोन्मे रिशः ॥ छिन्नाः कुंजविघट्टनैर्गि

रितटायेनाद्य माद्यन्बलादेरंडेस्स कथंन्तु गंड मिन्तराट्केड् यितुं
कांक्षन्तु ॥१५॥ रेस्तृथनाथगहना निविगाहमानो मस्ता सिपीदर्पं
ताना नि त्तिन सिरोलान्र॥ किंपेरुषं तववदा मि हरेः परोक्षं किं
नस्स मक्ष मथता निपलायेना नि ॥१६॥ लीयंतां मत्राकास्स्तत्
षु विहगागुच्छेषुगुल्मेषु वावल्लीषु भ्रमराः क्ष्रूपेषु स्स मराः श्च
भ्रेषु चषापदाः मध्ये क्नि घमत्ता महां सिरव दिरंगा रोय

॥२८

॥८॥

55

मान्युच्चिरत्युन्नतस्यमेरोपरंकरिपतेनस्त्येव विश्राममन्त्रः
॥१७॥ सरसिनसहस्राविनिष्पतेस्त्वंबहिरमलंकलयन्
विसारिवारि॥ द्विरदपरिवृढप्ररूढपंकैकतिकरिणो
त्रेमदालसानमग्नाः॥१८॥ आघोरणेनचरणेन निपी
डितोसिधिक्कष्टंखलामपिहठादिहलं॥ जितोसि
॥ घत्रोदरेकालमलुब्बमना निपत्यरेदूरथनाथसहसे

वक्त्रयं त्रणा नि ॥१९॥ साधो किमाघोरणदूयनाथं
गुष्टकेनाति तरां दुनोषि ॥ नो चेदयं वेद निजानुजा वंत
ज्ञस्य ते कर्तुमिदं न युक्तं ॥२०॥ तीर्णः कथं च न किरात
त्रासात् निपातान्मुक्तः कथं कथमपि स्कधितान्न रक्षोः
दुर्दैव वैज्ञव वशान्मृगशावको यमुद्दाम दावदहने
गहने निमग्नः ॥२१॥ कस्तूरिका हरिणमुं च वनोपकं

॥२९

ठं मासौरक्षेणकक्रन्तः स्फुरन्नीकुरुषु ॥ आस्तांयद्रोनकु किरा
शाराञ्जि याताज्ञाता पिहंनन्जविता न्जवतोदुरापः ॥२२॥ विलप
तितन्नु तेगनागता निस्पृह्य तिनव्यथिताकुशांकुरेन्युः ॥ अच
कमते निरीक्ष्यरुद्वमेणीह रिणामरुंत्कुदजांत वं धनानि ॥२३॥
लरितेननतरक्षदर्शनान्निज्जनरागावो पिमनाङ्ग वीक्षितः ॥ अ पुना रिणी
षुहंततेवल्लतेको पिकुरंग विक्रमः ॥२४॥ कुरुकुं चितचिल्लिपामराणां

॥३०।

नसमाज्ञेसरसानिकौशलानि।स्फुटदर्शनमत्र द्विलासो
ननुवैदग्ध्यमतिस्फुटैववाणी॥२५॥सूर्याचंद्रमसोघनैरति
घनैरेतोविलुप्तद्युतीस्वच्छंदंमलिनाःपरंज्ञलमुचोवर्षंति
गर्जंतिच॥कुल्याएवसरित्समद्रसरसीकुल्यावन्द्वःक्ष
णात्कालःक्रीडतिकौतुकंविरचयनकस्मैकिमाचक्ष्महे॥
॥२६॥अतुलरूपगुणोचितयोगयोःकमलिनीशशिनोरस

॥३०

मागमात्॥ अपयशो विधिना निजमर्जितं विनिहिता च जनस्य हृदि
व्यथा॥२७॥ परेषु लोकेषु विचिंत्य याचनां परो पि को नाम न यातु
नम्रतां॥ त्रिलोकनाथो पि यया दुरंतया हठादयं वामनतामनीयत॥२८॥
लज्जते लघुरप्येष सपक्षो पक्षमाश्रुगः॥ पक्षहीनतयाहं तन्न यत्नु
र्गुणवानपि॥२९॥ मणिरयमनुष्ण इति ते न पुनस्त्रिलायामुदेतु ना
श्वासः॥ अचिरेण तणिकिरणव्यतिकरमात्रेणादं दहीत्येषः॥३०॥

॥२१॥

घनपांसु विधूसरांशुराशिर्नमसो तापभयेसु धावधान ॥ अधि
चत्वर विपिपामरीणाममरी दुर्लभकस्तव प्रकारः ॥ २१ ॥ दी
र्णो सिचेन्क कनकस्तननिवेश्नानाय मुक्ताकलाप किमतो भवतो
विषादः ॥ यत्त्वं च वाण जयमंगल्हेमकुंभे कुंभस्तनीस्तनतटेन वि ॥२१
तानुषंगः ॥ २२ ॥ येनाकारि मही जनताम चिरतं कंठे षुलीला यि
तं येन प्रापि सरोजसुंदर दृशां तुंगस्तनालिंगनं ॥ ज्ञातं

61

येनगजेंद्रगंडपुलिनसा धारणांकुलयामुक्ता दामतदेवयाम
रपुरेनावापकांकांदत्रां ॥२३॥ अन्यापादेत्रा वि निवेत्रा विदग्ध
चु यैव धिश्री जाव विलासएषः ॥२४॥ सद्गुणानां समुद्रेण
रुद्रेणयथितामुणैः कंठस्थाकंठमालेयंकेषांनकुरुते श्रियं
॥२५॥ विद्या निवासपुत्रस्यन्यायवाचस्पतेरियंकाव्याला
प विदग्धानांमुदं निर्मातु निर्मितिं ॥२६॥ इतिश्रीजाव विला

[OrderDescription]
,CREATED=05.10.20 17:01
,TRANSFERRED=2020/10/05 at 17:08:54
,PAGES=63
,TYPE=STD
,NAME=S0003885
,Book Name=M-1595-BHAVVILASH
,ORDER_TEXT=
,[PAGELIST]
,FILE1=00000001.TIF
,FILE2=00000002.TIF
,FILE3=00000003.TIF
,FILE4=00000004.TIF
,FILE5=00000005.TIF
,FILE6=00000006.TIF
,FILE7=00000007.TIF
,FILE8=00000008.TIF
,FILE9=00000009.TIF
,FILE10=00000010.TIF
,FILE11=00000011.TIF
,FILE12=00000012.TIF
,FILE13=00000013.TIF
,FILE14=00000014.TIF
,FILE15=00000015.TIF
,FILE16=00000016.TIF
,FILE17=00000017.TIF
,FILE18=00000018.TIF
,FILE19=00000019.TIF

FILE20=00000020.TIF
,FILE21=00000021.TIF
,FILE22=00000022.TIF
,FILE23=00000023.TIF
,FILE24=00000024.TIF
,FILE25=00000025.TIF
,FILE26=00000026.TIF
,FILE27=00000027.TIF
,FILE28=00000028.TIF
,FILE29=00000029.TIF
,FILE30=00000030.TIF
,FILE31=00000031.TIF
,FILE32=00000032.TIF
,FILE33=00000033.TIF
,FILE34=00000034.TIF
,FILE35=00000035.TIF
,FILE36=00000036.TIF
,FILE37=00000037.TIF
,FILE38=00000038.TIF
,FILE39=00000039.TIF
,FILE40=00000040.TIF
,FILE41=00000041.TIF
,FILE42=00000042.TIF
,FILE43=00000043.TIF
,FILE44=00000044.TIF
,FILE45=00000045.TIF
,FILE46=00000046.TIF
,FILE47=00000047.TIF

FILE48=00000048.TIF
,FILE49=00000049.TIF
,FILE50=00000050.TIF
,FILE51=00000051.TIF
,FILE52=00000052.TIF
,FILE53=00000053.TIF
,FILE54=00000054.TIF
,FILE55=00000055.TIF
,FILE56=00000056.TIF
,FILE57=00000057.TIF
,FILE58=00000058.TIF
,FILE59=00000059.TIF
,FILE60=00000060.TIF
,FILE61=00000061.TIF
,FILE62=00000062.TIF
,FILE63=00000063.TIF
,